M. T. B. COLLEGE, SURAT

Manuscripts Library

No. Ref.

No. Ser. 273

Title: Ashvadana Vidhi

Later

273

अधिवासन विधिः

Ashivadana Vidhi	Title
	Author
	Editor
	Year, Vols.
	Publisher
273	Remarks

श्रीगणेशायनमः॥ देशकालौस्मृत्वा हयरोमसंख्यादिवस गंधर्वलोकवासानंतरंदिव्ययानानांप्राप्त
येअश्वदानंकरिष्ये॥ द्विजंवृत्वासंपूज्यवस्त्रादिभिः॥ अश्वंपूजयेत्॥ अश्वस्यांगेषुदेवताआवाह
येत्॥ ललाटेवरुणायनमः॥ वरुणंआवाहयामि॥ सटायांश्रियै॰श्रियंआ॰ नेत्रयोःभास्कराय॰भा
स्करं॰नासापुटयोःभुग्मुखाय॰भुग्मुखं॰जिह्वायांसरस्वत्यै॰सरस्वतीं॰दंतेषुराक्षसेभ्यो॰राक्षसान्॰
मुखेवैश्वानराय॰वैश्वानरं॰कर्णयोःऋषिभ्यो॰ऋषीन्॰स्कंधेहयग्रीवाय॰हयग्रीवं॰पृष्ठेपुरंदराय॰
पुरंदरं॰कट्यांअष्टवसुभ्यो॰अष्टवसून्॰पुच्छेनागेभ्यो॰नागान्॰गुह्येकामदेवायन॰कामदेवं॰नाभौत्रै
लोक्याय॰त्रैलोक्यं॰उदरेरुद्राय॰रुद्रंआ॰कुक्षयोःदेवेभ्यो॰देवान्॰कंठेयमाय॰यमं॰हेषायांकीर्त्यै॰
।कीर्तिं॰ऊर्वोः कुलाचलेभ्यो॰कुलाचलं॰चरणेषुवायुभ्यो॰वायून्॰खुरेषुपिशाचेभ्यो॰पिशाचान्॰
छायायांगंधर्वेभ्यो॰गंधर्वान्॰रोमकूपेषुपितृभ्यो॰पितॄन्॰रोमाग्रेषुचंद्रमसे॰चंद्रमसं॰द्वादशार्कमि
यायअश्वाय॰इतिमंत्रेणध्यानादि॥अर्घमंत्रः॥खुराग्रेणयथाभूमिंतथामेपातकंहर॥ ॐकारेणस
मस्तंचयद्दाऊनःकायकर्मजं॥ सूर्यरूपिणेअश्वाय॰इदमर्घ्यं॥ ततोस्नानादिभिःसंपूज्य॥ दानमंत्राः॥
उच्चैःश्रवकुलेजातोसर्वदेवमयोहयः॥ मयाजन्मार्जितंपापंत्वद्दानान्नाशयाशुभो॥ यथाभानुर्हयैर्गं
तुमपारंपारमिच्छति॥ महापापोदधेस्तद्वत्तर्तुपारंत्वयाददे॥ स्वर्गंचमोक्षपद्धाश्चक्रीडयिष्येसुरैःसह॥

त्वद्दानतोद्द्यंश्रेयंयावदादित्यसंस्थितः॥ उच्चैश्रवसमश्वानांराज्ञांविजयकारक॥ सूर्यवाहनमस्तुभ्यम
तःशांतिंप्रयच्छमे॥ अमुकगोत्रोमुकशर्माहंअमुकगोत्रायामुकशर्मणेब्राह्मणाय इममश्वंपंचप्रमा
णानिर्मितरौप्यशफसहितंशत्त्यासुवर्णा सनातंकृतंवस्त्रसहितंचवरुणदेवतंममहयरोमसंख्या
दिवसगंधर्वलोकवासानंतरंनानादिव्ययानानांप्राप्तिकामायतुभ्यमहंसंप्रददेतिद्विजहस्तेसाक्षतम
कुशजलंप्रक्षिप्यनममेतिवैदेत्॥ विप्रेणदक्षिणकर्णेप्रतियह्यः॥ अश्वतत्तीयांशदक्षिणा इति अश्वदानं॥